M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref.

Ser. 967

Title: Batuka Bhairava Stotra

967

in Complete

C

: Batuk	: Bhairav Stotra	: Title etc	
:	:	: Author	
:	:	: Editor	
:	:	: Year, Vols.	
SK :	:	: Publisher	
967 :	:	: Remarks	

मः श्रीगणेशायनमः ॐ जगनायैनमः श्री
श्रीइंद्राक्षीदेव्यैनमः इंद्रा
क्षीस्तोत्रस्य पुरंदरऋषिः अनुष्टु
प् छंदः इंद्राक्षीदेवता लक्ष्मी
बीजं भुवनेश्वरी शक्तिः सर्वको
मार्थसिध्यर्थं जपे विनियोगः॥
इंद्राक्षीनाम सा देवी देवतासमुदे
ता॥ गौरी शाकंभरी देवी दुर्गाना
म्नीति विश्रुता॥१॥ कात्यायनी महा
देवी चंद्रघंटा महातपा सावित्री
त्रिसा च गायत्री ब्रह्माणी ब्रह्म
वादिनी॥२॥ नारायणी भद्रकाल
ली रुद्राणी कृष्णपिंगला अग्निज्वा
ला रौद्रमुखी कालरात्रि तप
स्विनी॥३॥ मेघश्यामा सहस्रा
क्षी ... गा जे ...

श्रीः पार्वत्यंबायैनमः श्री देवी उवाच॥ कौलीप
ज्ञा सुतानघ भाव अविधो विस्मृताः इदानीं श्रो
तुमिच्छामि कवचं मंत्रसूचितं॥१॥ त्रैलोक्य नम्य
त्वाहिमां दुःखसंकटात्॥२॥ भैरव उवाच॥ रहस्यं
शृणु वक्ष्यामि भैरवि प्राणवल्लभे॥ पठि
~~त्वा धारयित्वा च~~ श्रीजगन्मंगलं नाम कवचं
मंत्रविग्रहं॥३॥ पठित्वा धारयित्वा च त्रैलो
क्यं मोहयेत् क्षणात्॥ नारायणोपि यत्पठ
त्वा नारी भूत्वा महेश्वरं॥ योगेश्वरं क्षोभमन
यत् यद्धृत्वा च रघूद्वहः॥५॥ वरदृप्तान् जघा
न एव रावणादिनिशाचरान्॥ यस्य प्रसादादी
शोपि त्रैलोक्यविजयी प्रभुः॥६॥ धनाधि
पः कुबेरोपि सुरेशोभूच्छचीपतिः॥ एवं हि
सकला देवाः सर्वसिद्धीश्वराः प्रिये॥७॥ श्रीज
गन्मंगलस्यास्य कवचस्य ऋषिः शिवः॥ छं
दोनुष्टुप् देवता कालिका दक्षिणेरिता
जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु॥ योषि
दाकर्षणे चैव विनियोगः प्रकीर्तितः

दरामुक्तकेशी घोरारूपा महाब
ला ॥ आद्रिजा नंदजा मत्रा राग
हेत्री शिवप्रिया ॥ शिवंदुती क
ली घप्रसदा परमेश्वरी ईश्वरा
ईश्वरूपा च ईश शक्ति परा पर
वाराही नारसिंही च भीमा भैर
व नादिनी ॥५॥ श्रुतिः स्मृति धृ
ति मेधा विद्या दमी सरस्वती
श्रीदा विद्या मनसा मान स्तोका
पराजिता ॥६॥ भवानी पार्व
ती दुर्गा हैमवत्यंबिकारिका ॥
एतैर्नामपदैर्दैः स्तुता शक्ते
ण धीमता शत मावर्तये च
स्तु स्तु मुच्यते व्याधिबंधना
त ॥ आवर्त्तन सहस्त्रेण लभते वां
छितं [illegible] ली [illegible] श्री इत्यादौ [illegible] तोत्रं

रा मे कालिका पातु श्रीकारे का त्तरा परा ॥ श्री
…ी श्री मे ललाटं च कालिका खड्ग धारिणी ॥
हूं पातु नेत्र युग्मं ह्रीं ह्रीं पातु श्रुती मम ॥ दक्षि
ण कालिके पातु घ्राण युग्मं महेश्वरी ॥ ७ ॥ नं
…क्री क्रीं रसमां पातु ॐ हुं हुं पातु कपोलकं ॥ व
दनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी ॥ ११ ॥
…विंशाक्षरी स्कंधो महाविद्या सुख प्रद
… खड्ग मुंडधरा काली सर्वांगमभितोऽवतु ॥ १२
…ी हूं ह्रीं ह्रीं त्र्यक्षरी पातु चामुंडा हृदयं मम
…हूं स्तन द्वं द्वं पातु स्वाहा ककुप् पक्षदक्षरी मह
…या …जो पातु सर्व …का ॥ १३ ॥ क्री क्री हूं हूं ह्रीं
…कारी पातु षडक्षरी मम ॥ श्री नाभिं मध्य दे
…शे दक्षिणे कालिके वतु ॥ १४ ॥ श्री स्वाहा
…पद पंच कालिका सा दशाक्षरी ॥ ह्रीं ह्रीं दक्षि
णे कालिके हूं ह्रीं पातु कटि द्वयं ॥ १५ ॥ काली
दशाक्षरी स्वाहा पातु जानुनी कालिका सदा
मा मस्तु युग्मं को ॥ ॐ ह्रीं श्री मे स्वाहा ॥ १६

य
ॐ हरायनमः मदो
हरणे। ॐ महेश्वराय
नमः संबहनी। ॐ शूल
पाणयेनमः इति पाठ
स्थापनी। ॐ पिनाकिनेनमः
आवाहनी। ॐ पशुपतये
नमः स्नांनी। प्रास्य मंत्रस्य
वामदेवऋषिः पंक्ति छंदः
सदाशिवो देवता ॐ बीजं
नमः शक्ति मम मनो ष्टसि
ध्यर्थं जपे विनियोगः।
वामदेवाय ऋषयेनमः
शिरसि पंक्ति छंदसे नमः
मुखे सदाशिवायनमः

बटु ॐ श्रीबटुकनाथायनमः ॥ ई
॥ मेरुपृष्ठेसुखासीनं देवदेवं
जगद्गुरुं । शंकरं परिपप्रछ
पार्वती परमेश्वरं ॥१॥ श्रीदेव्यु
॥ भगवन्सर्वधर्मज्ञ सर्वशास्त्रा
॥ स्त्रागमादिषु ॥ ःआपदुद्धार
॥ णंमंत्रं सर्वसिद्धिप्रदं नृणां ॥ २ ॥
॥ सर्वेषांचैव भूतानां हितार्थी
॥ वांछितं मया ॥ विशेषतस्तु
॥ राज्ञां वै शांतिपुष्टिप्रवर्धनं ॥ ३ ॥
॥ ःअंगन्यासकरन्यासदेह
॥ न्याससमन्वितं । वक्तुमर्ह
॥ सि देवेश मम हर्षविवर्ध
॥ नं ॥ श्री ई ःपस्य श्रीःपाप

। आपम

दुद्धारस्तोत्रमंत्रस्य बृहद
रण्यक ऋषिः ःपनुष्टुप्छं
दः श्री मैवे देवता ःपांबी
जं ह्रीं शक्तिः ह्रं कीलकं ःपा
पक्षिवातार्थे वजु विधपुर
ष्यये सिध्यर्थे जपेविनियो
गः ॥ ह्रां वां ःपंगुष्ठाभ्यांनमः
॥ ह्रीं वीं तर्जनीभ्यांनमः
ह्रूं वूं मध्यमाभ्यांनमः ॥
ह्रैं वैं ःपनामिकाभ्यांनमः
ह्रौं वौं कनिष्ठिकाभ्यांनमः ॥
ह्रः वः करतलपृष्ठाभ्यांनमः ॥
॥ श्रीशंकर उवाच ॥ श्रणु दे
वि महा ह्ता मंत्रे ःपापदुद्धार

बटु
हेतुके सर्वदुःखप्रशमनं स
र्वशत्रुविनाशने ॥५॥ ःपप॥
एगो३ स्मारादिरोगाज्वरादीनो वि
शेषतः ॥ नाशनं स्मृति
मात्रेण मंत्रराजमिमं प्रिये ॥
६॥ ग्रहराजभयानां च नास
नं सुखवर्धनं स्नेहाद्धा
शामि ते मंत्रं सर्वसारमिमं
प्रिये ॥७॥ सर्वकामार्थदं
देवि राज्यभोगप्रदं नृणां ॥
ःपापहृद्धारकं त्वं मंत्रं तन्त्र
वरूपान्प्रयोषतः ॥८॥ प्रण
वं पूर्वमुच्चत्य देवीप्रणवं
मुच्चातेब हुकायेति वेपश्चा

। अपाम

दापदुधारणाय च ॥ कंकथ
येत ततः पश्चाद्बटुकायेतिनि
स्थिपेत ॥९॥ देवीप्रणवमु
च्चत्य मंत्रोधार मिमं प्रिये ॥
मंत्रोधारमिमं दद्वी त्रैलोक्य
स्यापिदुर्लभं ॥१०॥ ःपप्रका
रांपरं गुह्यं विसर्वशक्तिस
मन्वितं ॥ श्रवं णाद्विमंत्रं
स्य भूतप्रेतपिशाचकाः ॥११
वि ऊ वंत्यति भीता वै काल
रुजादिव प्रजाः ॥ पठेद्वापाठ
ये द्वापि पठंतो द्वापि दुःस्वं
॥१२॥ नाग्निचौरभयं तत्र

श्रीरामसत्य

अंजन्यास्तनयः समीर
णसुतोयः फाल्गुनेयोद्भ
वः श्रीरामप्रणयैकध्या
मविलसत्सत्यप्रतिज्ञो
3 निधिः पिंगाक्षोद्भूतविक्र
मोजलनिधोरुल्यंघने
धिराधीः सौलौत्पाटित

सैलश्रृंगघटितप्रत्यग्र
सेतुस्थितिः ।१। लंकाधीश्व
रदर्पहा जनकजासोकांत
कृतलक्ष्मणः प्राणत्राणक
रोजितेंद्रियचयः श्रीमानहनु
मानन्वटः एतैर्नामभिराहृ ततः
प्रतिदिनं निद्राक्षयेकीर्त्तिनात् ६
तेषमुद्धरति ध्रुवंहृयगतानि
त्यत्रितीयोज्वरं ॥

स्वराज मैं यंतथा ॥ नवम्यो
रीभयश्चैव सर्वत्र वसु
धी भवेत ॥१३॥ इपादुराधे
ष मे श्वर्यं पुत्रपोत्रादिसं
पदः । भवंति सततं तस्य
पुस्तकस्यापि पूजनात ।
॥१४॥ श्रीपार्वत्युवाच ॥ य
स एष भैरवो नाम ॥ पाप
दुधारणो मतः ॥ बटुका
ख्यो तो दव भैरवः क
स्य सुतमः ॥१५॥ तस्य ना
म सहस्राणि प्रयुतान्य बु
दानि च ॥ सार मुद्धृत्य
तेषां वै नामाष्टशत कं

बदा ॥१६॥ यानिसंकीर्त्य य
न्मर्त्यः सर्वदुःखविवर्जितः ॥ स
र्वान् कामानवाप्नोति साध
कः सिद्धिमेव च ॥१७॥ श्रीशं
कर उवाच ॥ श्रृणु देवि प्रवक्ष्या
मि भैरवस्य महात्मनः ॥ आ
पदुद्धारकस्येदं नामाष्टशत
मुत्तमं ॥१८॥ सर्वपापहरं पु
ण्यं सर्वापत्ति निवारणं ॥ स
र्वकामार्थदं देवि साधकानां
सुखावहं ॥१९॥ नामाष्टशत
कस्यास्य छंदोनुष्टुप बुदाहृ
तं ॥ बृहदारण्यको नाम ऋ
षिर्देवोथ भैरवः ॥२०॥

बटु

॥ भैरवं महर्षिविन्यस्य
ललाटे भीमदर्शनं ॥
दग्धो मृतासयं न्यस्य
हृत्कर्णयो मृतेनाय
कं ॥२१॥ त्रिनेत्रं कंठम
ध्ये तु स्तोत्रं पाले स्थि
न्पि स्तोत्र ॥ देवं पना
त्रिदशोत्तु कथी सर्वी
धेनाशाने ॥२२॥ रक्षा
क्षं महवीं विन्यपञ्चयो
रक्तपानकं । पादयो
दिव्यदेवेशं सर्वांगे
बटुकं न्पे स्तोत्र ॥२३॥

। श्रीराम

करकलितकपालः कुं
डली दंडपाणिस्तरुणति
मिरनीलव्यालयज्ञोपव
ती क्रमसमयसपर्यावि
घ्नविच्छेदहेतुर्जयति ब
टुकनाथः सिद्धिदः साध
कानां ॥२४॥ अथ ध्यानं
प्रवक्ष्यामि यथा ध्याया
पठेन्नरः । शुद्धस्फटि
कसंकाशं सहस्रादि
त्यवर्चसं ॥२५॥ नीलजी
मूतसंकाशं नीलांजन
समप्रभं ॥ अष्टबाहुं त्रि

द का ॥श्रीगणेशायनमः॥ अस्य श्रीदक्षिणाका
लिकामंत्रस्यभैरवऋषिः उष्णिक्छ
न्दः श्रीदक्षिणाकालीदेवता ह्रीं बी
जं हूं शक्तिः क्रीं कीलकं ममाभीष्ट
सिध्यर्थे जपे विनियोगः ॐ भै
रवऋषये नमः शिरसि उष्
णिक्छन्दसे नमः मुखे
श्रीदक्षिणाकालिकादे
वतायैनमः॥ हृदये ह्रीं बीजा
यनमः॥ गुह्ये हूं शक्तयेन॥
मः पादयोः क्रीं कीलकायन
मः॥ सर्वांगे इति ऋष्यादि
न्यासः॥

। श्रीराम

॥ॐ क्रां अंगुष्ठाभ्यांनमः॥
॥ॐ क्रीं तर्जनीभ्यांनमः॥
॥ॐ क्रूं मध्यमाभ्यांनमः
॥ॐ क्रैं अनामिकाभ्यांन
मः॥ॐ क्रौं कनिष्ठिका
भ्यांनमः॥ॐ क्रः करत
लपृष्ठाभ्यांनमः॥ॐ क्रां
हृदयायनमः॥ॐ क्रीं शि
रसेस्वाहा ॐ क्रूं शिखा
यैवषट् ॐ क्रैं क
वचायहुं ॐ क्रौं नेत्रत्रया
यवौषट् ॐ क्रः अस्त्राय
फट्॥ श्रीभवानीजीरा
ल के शुभंभवतु

बटु
नयनेचन्द्रवह्निदिवाक
रे॥२८॥दृष्ट्वाकरालवद
७ नं नृत्यरावसंकुलं॥
भुजंगभैरवं देवम॥
शिवं खशिरोरुहं॥२९॥
दिगंबरं कुमारं त्रीं ब
टु कौरवं महाबलं॥ ब
हुंग मल्लिपाशौ च भ्रातं
चैव तथा पुनः॥३०॥ उम
रूप कपालं च वरदं भु
जंगं तथा॥ ःपात्मवलं

२ समोपतंसरमेयसमन्वि
तं॥२९॥ध्यात्वा जपेत्सु संतु
ष्टः सर्वान्कामानवाप्नु
यात॥ एवं ध्यात्वा ततो दे
वि भैरवस्य महात्मनः
॥३०॥ भैरवः संप्रविष्टस्या
त स स्वयं परमेश्वरः सं॥
तोषं परमं प्राप्य भैरव
स्य महात्मनः॥३१॥ ॐ
ह्रीं भैरवो भूतनाथश्च
भूतात्मा भूतभावनः॥

। ७ श्रीरामश्रीरामसत्य

श्रीराम श्रीराम श्रीराम श्रीराम श्रीराम श्रीराम
श्रीराम श्रीराम श्रीराम श्रीराम श्रीराम श्रीराम

८

८

अ त मा न श्री सं ज म तो उप
पुरा हुग सताव हा सी ल त्रप
द ठि मी त त्र पि प न कु रु पा
पुत्रान वारी शा [illegible] द्व ते यात्त
रा त्मा श्री॥ कु मा सन्ने ते गरु
ग सना त्र कु न ज थं जे
श्री त कु स्तु जा त्र लं श्री
क ल न्ना ये कु म सू दे वे पा
श्री ते कु व य ना त्र मस्त श्री
डे न स्तु तं जा ग व त पुरा
ए ना रा द्ध ता डे न पु ज पु

संपूर्ण

रा पुं रुतं मु मे जे न द्वरा मरा जा
तुनर व्रन्या जे न म गता न रा पुं
॥७

[illegible]द: द्योत्रपालश्च द्योत्र
[illegible] स्त्रियो विराट्॥३२॥
[illegible]शीर्षवासी मासाशीष पि
[illegible]शी स्मरो तकतारल्पापा
नप: सिद्धसिद्धिद: सिद्धसे
वित:॥३३॥ कंकोल: कोलश्च
यमन: कणो काष्ठा तनु: कवि
नेप त्रिर्भौमो बहुनेत्रश्च तप्ताप्ति
गलो धन:॥३४॥ शूलपाणि
खड्गपाणि: कंकालीघ्नसो
धन: पद्माक्ष भैरवो नाप्यो
मृत पोयोगिनिपति॥३५॥

धनदो धनहारी च धन
वान्प्रतिभानवान्॥ नाग
हारो नागपाशो व्योमकेश
कपालभृत्॥३६॥ कोलक
पाल: मालीच कमनीय क
लानिधि: त्रिलोचनो ज्वल
नेत्रश्च त्रिशिखोच त्रिलोक
प:॥३७॥ त्रिनेत्री ऊनयो
डि नेशो तेशो तजनप्रिय:
बहुको बहुकेशश्च बहा
गवरधारक:॥३८॥ भू
तोध्यद: पशुपतिर्भिक्षु

१ श्रीराम

कं परिवारकः ॥ धत्तौ दिगंब
रः शौरिः सुरिणपः पांडुलो वन
॥१९॥ प्रेशोतातशांतिदः शुध
शोकरः प्रियबांधवः ॥ प्रबुम्र
१० ॥ त्तीनिधिश्च श्मशानवस्तु
स्तपोधनः ॥२०॥ प्रबधारष
ठोधारः सर्पवृत्तः शिखिवा
सरवः ॥ धरो म्हधराधीशो
पतिर्धराखजः ॥२१॥
कंकालधारी मुंडीच व्याघ्रय
ज्ञोपवीतकः ॥ जंगोलो मोह
नस्त्रैभीमारण सोमरूस्त
पा ॥२२॥

श्रुद्धानिसोऊन प्रसोदैत्या
त्मा मुमुक्षुभिनः ॥ वैबलिजु
म्रलिजुग्राप्या बाजोबाजप
राक्रमः ॥२३॥ सर्वापत्ता र
क्षो दुर्गो दुष्ट तनिषवि
नः ॥ कामाकलानिधिः का
तः कामिन्निवासकः धरा
॥२४॥ सर्वसिद्धिप्रदो वैद्य
प्रभुर्विष्णुरितीव हे ॥ प्र
बोतरस्तेनामानि भैरवस्य
महात्मनः ॥२५॥ मयातक
थितं सर्वं रहस्यं सर्वकामि
कं ॥ यइदं पठते नित्यं नैना
मोवशतम्नुतम ॥२६॥

बहु नतस्य दुरितं किंचिन्नच मृतवा
यं क्वचित। नचमारी भयं किंचि
तन्नरोगा एगं भयेतथा॥४७॥ न
शत्रुभ्यो भयं चैव प्राप्नुयात्वान
११ वं क्वचित्पातकानां भयं नैव।
पठेन्स्तोत्रमनुत्तमं॥४८॥ मार
भयराज भयेतथा चौराग्निजे
भये। कृत्यादिके साततघोर
तथा दुःस्वप्नजे भये॥४९॥ बं
धनेच तथा घोरे पठेस्तोत्रम
नन्यधीः। सर्वप्रशममायां
ति भयं भैरव कीर्तनात॥५०॥
एकादशसहस्रं तु पुरश्चर
णमुच्यते। यस्त्रिसंध्यं पठे

सेवत्सरमतंद्रितः
प्नुयादिष्टं दुर्लभा
संभ्रमिकामस्तु
तं॥५२॥ रात्रौ श
ठेत्पास्तव कं न
चैवं नाशयात्प्रव
ज पेन्मासत्रयम
मानयेत धनार्थी
प्नोति मानव
सत्रं यादविवार
मेकंतथा निशि
रोगी रात्रमुक्तो

देवि
विप्रा
पठत्य
पन्मे
र्घ्ये प
गे ध
॥५३॥
वश
दार
पठेत्वा

॥५१॥ सम्य
दपि मानवः
जपि वा प्राप्नु
यु विनाश ॥
थ्या। रात्रौ वार
शां त्रैवानं ॥
त्यौ राजानं
वस्तु तथ्यैव
॥५४॥

बटु

त बद्धो मुच्येत बंधनात ॥५५ १२
नव त्परो गो कृति मान बलरूप
गुणान्वित: नीतो नयात्प्रमुच्ये
त देवैस त्पन स सय: ॥५६॥
:पप्रकाशंपरं गुह्य मदेयेय
१२ स्यकस्य चितास्तु ऊजीनाय
शांताय स्द्द्यिदंनवर्ज्जि ते॥
दद्यात्स्तोत्रमिदं पुण्यं सर्व
कामफल प्रदं ॥५७५८ ५९॥
इति रुद्रयामले उमा महे
श्वर संवादे श्रीबटुकभैर
वापदुद्धार एनामाष्टो त्तर

शतनामस्तोत्रं संपू
र्णसमाप्तं ॥श्री॥
॥छ॥छ॥श्री॥ ॥
शुभं भवतु ॥श्रीरस्तु ५१
॥कल्याणमस्तु ॥
संवत १९३८ वर्षे मा
घ शुदी ८ वार शुक्रे
लीषीतं पानि त्य
नंद भवानीद सा
मारे छे वाको सर्व मे
प्यागण पति त बोमीप दो

। श्रीराम

१३ ॥ ॐ श्रीगणेशायनमः॥ ॐ नमः
नमः श्रीप्रत्यंगिरादेव्यै॥ ॐ
प्रत्यंगिरास्तोत्रमंत्रस्य मा
हादेव ऋषिरनुष्टुप् छंदः
प्रत्यंगिरा देवता मम अभिष्ट
सिध्यर्थे जपे विनियोगः॥
मंदरस्थं सुखासीनं भग
वंतं महेश्वरं॥ समुपागम्य
चरणौ देवी निपप्रछतं
१ श्रीदेव्युवाच। कारिणाप
रमा विद्या प्रत्यंगिरा सुरा
ष्या लोकनारिहिताथोये।
बोलोनां रक्षणाय च॥२॥

१३ राज्ञां मंडलीकानां चदीनानां च म
महेश्वर। विप्राणां च द्विजातीनां
विशेषेण सर्प साधिनी॥३॥ सह
न्येषु घोरेषु विषुदग्निन्येषु
च। व्याघ्रदंष्ट्रिकरात्रौ तैनेनदे
नदसमुद्रजे॥४॥ व्यभिचारेषु
सर्वेषु घोराज्ञन्येषु च। सौभाग्यज
ननेनित्यंन एव वश्यकर्षेषु या॥५॥
तां विद्यां भोः सुरेशानकथयस्व
मम प्रभो॥ श्रीमहादेव उवाच॥
साधु साधु महाभागे जंतूनां हि
तकारिणि॥ तां विद्यां भो सु
रेशानि कथयामि न संशयः॥

१८

देवी प्रत्यंगिरा विद्या सर्वग्रह
निवारिणी सिद्धिनी सर्ववि
द्यानां सर्वपाप प्रमोचनी ॥ ख
वा सप्रभतीनां च जंतूनां हि
त कारिणी ॥ ८ ॥ सौभाग्य जन
नी देवी बल पुष्टि करी तथा
॥ धतुः पथेषु चौरेषु वनेषूप
वनेषु यथा ॥ संग्रामेषु ग्रमे
॥ चौरे सर्पचौरादि संकुले घोरे
दारुणी दुर्भिक्षे महा भय
उपस्थिते ॥ १० ॥ पवित्रा पवित्रा ता
देवी सर्व सिद्धि करी तथा ॥
विद्यानामुत्तमा विद्या धारि
ता वाचितुम नो ॥ ११ ॥ लिखि
तौ

तौ
ता करकेष बौ वाहू शिरसि ॥
॥ धारिता ॥ विमुच्यते महाघो
रैर्म स्यों भयदुरासदैः ॥ १२ ॥ ग्र
हा श्चैवास्य सिद्ध्यादेवराच्च
सपन्नगाः ॥ नतस्य पीड़ां कुर्वंति
ये चान्येपि द्रका ग्रहाः ॥ १३ ॥ मंत्र
चापविधारा श्च नतस्य प्रभवंति
वै ॥ नित्यं धारयमाणस्य प्रयत्न
वं प्रकल्पयेत ॥ १४ ॥ योधारयेचे
गयुक्तं तस्य रक्षा नवेश्यदा च
रिता वाचिता विद्या सर्वसिद्धि
करी स्मृता ॥ १५ ॥ वस्यां गस्यास
दा विद्यातस्य सिद्धि करी स्मृ

। श्रीराम

नायस्मींगस्यासदाविद्यात्र
त्वंगिराशिवोदिता॥१६॥दासि
खोनांसिविदानित्यंविद्ये
यंपरमास्मृता॥श्रीमताघो
रस्तूपेणभाषिताघोरस्तू
२५ पिण्या॥१७॥प्रत्यंगिरासदा
प्रोक्तारिपुहृत्रीनसंशय
हृत्रिपुंदनमिश्रेणरोषा
ना॥ॐॐमेनघा॥१८॥लि
खिवायाज्ञपत्रेषुध्या
रिणीयासदानपैःपुष्प

धूपविधिवैश्वबन्धुपत्र
रपूजनै॥१९॥पूजयिवा
यथान्यायंशतकौमेनवे
ष्टिता॥धरयेचइमांविद्यां॥
लिखिवा रिपुहावसः॥२०॥
विलयंयां तिरिपवः प्रत्यंगि
रावध्सर शातायचस्य
शक्तिहृस्ते नैवचरवादति
जिह्वया॥॥ २१॥ न्पसूत्रंतद्र
वि[illegible]वंनो पम्नत्पुःकल्पवं

१६ णकर्मणियोजयेच्च सुकृति मं
त्रस्य गंससाः॥२२॥मक्षितुज
रत्वाश्च तत्समात् सच्चस्तु व देत
वास्यापि वैमानाय्यो गौघ्न
नात्रसंशयः॥२३॥मंत्रेश
जो यदंदे वि सर्वसिद्धिक
रस्मृतः सर्वाविद्याविना
शीघ्रगोलकैमंत्रराट्स
दा॥२४॥सर्वविद्याहरा
विद्याप्रत्यंगिरामदे श्वरि
प्राप्नोति वस्तु ध्यं सर्वारि
पुत्रसौभाग्य दोश्रियां॥२५॥
वशर्पिकं च सिद्ध्यति तस्य

वशात्रैव प्राणहारकाः भवंतिवश
गाकस्य सौदर्यप्रियदर्शिनात्॥२६
ष्पवश्यातो वश्यतां यांति सिद्धिदेव्या
प्रसादतः॥चराचरमिदं सर्वं स्थै
भवनकानने॥२७॥नरनारी
कौएं साधकस्य वशस्तु वर्तते सर्वदा
वश्यतां यांति यजमानस्य तस्य
सवै॥२८॥गोलकस्य प्रभावे
नप्रत्यंगिराप्रसादतः त्रिपु
रश्च भयादस्यो इमां विद्यां
स्तु बिभ्रता॥२९॥निर्जिता
श्चासुराः सर्वे दैवैर्विद्या
प्रनंदिभः गोलकं संप्र
विक्ष्यामि भैवज्यं भवस्तु
श्रुते॥३०॥कांता मदनक

धैवकंकमंरोवनंतथा। कंकोलं
प्रत्यं वशिवारिषंसिध्वार्घ्यमाजनी
तथा।३१॥ एतत्द्रव्यमयं मु १७
गोजगमे निपातितः प्रत्व
तव्यारपेन्नमेत्रं साधकोमंत्र
विसदा।३२। पद्मुनोसंप्रवि
ष्यामि प्रत्यंगिरास्तु भाषिते
दिव्ये मंत्रप्रदे शिवे सुखोपा
ये सुखप्रदे॥३३॥ परिरक्षे
८ ध्याकिंचमनेन मंत्रराजप्र
कीर्तितः॥ ॥ःपद्यातोमंत्र
७। पदानि॥ ॐ नमः शिवायरु
द्रस्वमूर्तये सहस्रसूर्ये
एगयः पनादिरूपाय पुरु
हूताय महामखाय म

श्रीः

पिने महेश्वराय जगशांतिका
रिणेशांताय सर्वव्यापिने महा १२
घोरायातिघोराय॥ ॥ॐ ॐ ॐ मि
त्रमोवंशरया॥२॥ ॐ ॐ ॐ ह्रिपिर
ॐ ॐ ॐ हविर ॐ ॐ ॐ विघ...हुंहुं
लरप्रज्वलरप्रवलर वधर मथर
क्रमथरप्रधं सयरग्रसर पिबर
रायरत्रामयरदर रविदर रत्रासयर
विदारयरर रक्षावंरमांसाधकस
परिवारकंर रक्षोर सर्वोपद्रवेभ्यः
स्याता॥ ॐ र र र र र सर्व भवोपद्रवे
भ्योमहामे घोधाग्नि सर्वतकि
विद्युदर्क भूतिकपदि दिव्यकने
कांगोरूत्ते विकेषमालाधरशि
तिकं ठकपालमंत्राघ्राणिनेको

ॐ थत्यरमेश्वर प्रत्येछिंधि र भिंधि र वि
जीवयर देवपि तैच पिशाच नागासु
प्र.पं र गरूड किंनर विद्याधर गणगं
धर्व यक्षराक्षसस्तान लोकपा
न्नोग्रहांश्च स्तं नयर येवसदैमम
धारकस्पराञ्चवः स्तानि दोतय र
येवसदा मम धविद्या कर्म ॐ वं तित
षामविद्यांस्तंभयर तेषांच स्थानंकी
१८ लयर तेषांग्रामंकी लयरते षांघा
तयुर ॐ विश्वम तैयेमहा तेजसो
॥ ॐ यंयं मम शत्रुणाम विद्यांस्तं
नयर मम शत्रुणां मुखं स्तंभ
यर मम शत्रुणां नेत्रे स्तंभयर मम शत्रुणां
दंतान् स्तंभयर मम शत्रुणां जिह्वां स्तं
भयर मम शत्रुणां हृदयं स्तंभयर
मम शत्रुणां हृसौ सौं नयर मम श

त्रूणां गुह्यं स्तं नयर ममशात्रूणां पादौ स्तं
नयरम मशात्रूणां मिंद्रियाणि
शात्रूणां मिष्ठानि स्तं नयर मम
शानिस्तं नयर मम मशात्रूणां ॐ य
रम मशात्रूणां स्थानंकी जय
ग्रामंकी लयर ममशात्रूणां
ॐ सर्व सिद्धि सिद्धे महामा
गेम मधारकस्प सपरिवारकस्प सर्व
तोदां ॐ कूर स्वाहा
स्वाहा: ॐ ॐ फट् फट्
लंलंलं ॐ यंयंयंयंयं ॐ रंरंरंरंरं ॐ लंलं
१८ बों ॐ वंवंवंवंवं ॐ धुंधुं धुं ॐ धों धों ५
ॐ ह्रीं ह्रां ह्रां क्लीं ह्रां ॐ हुं हुं हुं हुं॥
फट् स्वाहा॥ ॐ प्रत्यंगिरे महाविद्ये म
मधारकस्प सर्व स्प सर्व तोरदां ॐ कूं
र स्वाहा॥ ॐ यः यः रः रः ॐ चं ह्रः हीं
फट् स्वाहा॥ ॐ नमो भगवत्पु छि षष्ठां
उलि त्रिशूल वज्रांकुश शाक्ति धारिणि
रुधिर मांस भक्षिणि एकपा॥

रवक्षां गव राधा हृलि म स साधक
स्य सपरिवार स्य के सर्वतो रक्षां कु
रु स्वाहा॥ मम शत्रुणां साध्य सा
धकं कर्माणि दह दह दह हन रक्ष मम स
र्वत्र मम सर्वदुष्टान् ग्रस ग्रस॥ ॐ ॐ ॐ
हूं हूं हूं दंष्ट्राकरालिके मम कृते यंत्रम
न्त्र तंत्र विषधूप शस्त्राद्याभिचार
सर्वोपद्रवादिकं येन केन कारितं
कुरुते कारयिते करिष्यति का
रयिष्यति वा तान् सर्वान् हन हन द
ह प्रत्यंगिरे रक्ष रक्ष रक्ष मां साध
कं सपरिवारकं रक्ष रक्ष स्वाहा
ॐ फं फं फें हूं हूं फुट् स्वाहा॥ ॐ ऐं
ह्रीं श्रीं ब्रह्माणि मम शिरो रक्ष रक्ष
स्वाहा॥ ॐ ऐं ह्रीं श्रीं माहेश्वरि म
मम नेत्रे रक्ष रक्ष स्वाहा॥ ॐ ऐं ह्रीं
श्रीं कौमारि मम वक्त्रं रक्ष रक्ष स्वा
हा॥ ॐ ऐं ह्रीं श्रीं वैष्णवि मम कंठं
रक्ष रक्ष स्वाहा॥ ॐ ऐं ह्रीं श्रीं नारसिं॥

ह्रीं मम हृदयं रक्ष रक्ष स्वाहा॥ ॐ
ॐ फं फें हूं हूं फुट् स्वाहा॥ ॐ ऐं ह्रीं श्रीं
वाराहि मम बाहू रक्ष रक्ष स्वाहा॥ ॐ ऐं ह्रीं
श्रीं नारसिंहि मम नाभिं रक्ष रक्ष स्वाहा
॥ ॐ ऐं ह्रीं श्रीं चामुंडे मम गुह्यं रक्ष रक्ष स्वा
हा॥ ॐ ऐं ह्रीं श्रीं चंडिके मम जंघे रक्ष रक्ष
स्वाहा॥ ॐ ऐं ह्रीं श्रीं विश्वेश्वरे मम पादौ र
क्ष रक्ष स्वाहा॥ स्तंभनी मोहनी च वश्यो
मणा द्राविणी तथा जंभणी भ्रामणी
पेडी तथा संहारिणी ति च यस्त्रैकं क्र
मयोगेण शत्रुपक्षे नियोजिता॥ धम
णो साधकेन्द्रेण सर्व नि शत्रु विना
शिनी॥ ॐ स्तंभनि स्फें स्फें मम
शत्रून् स्तंभय॥ ॐ मोहिनि स्फें स्फें
मम शत्रून् मोहय॥ ॐ द्राविणि
स्फें स्फें मम शत्रून् द्रावय र॥ ॐ
जृंभिणि स्फें स्फें मम शत्रून् जृं
भय॥ ॐ भ्रामणि स्फें स्फें मम शत्रू

न ऊर्जय२॥ ॐ भ्रामणि स्फें स्फें मम शत्रू
न् भ्रामय२॥ ॐ रौद्रि स्फें स्फें मम शत्रू
न् संतापय२॥ ॐ संहारिणि स्फें सां मम श
त्रून् संहारय२॥ य इमां धारयेद्विद्यां
त्रिसंध्यं यः स्मरेदपि। सोपि दुःखरवं
तगो देवि हन्यात् शत्रून्न संशयः॥
सर्वतो धारयेद्विद्यां महाभयविप
२० त्तिषु महाभयेषु घोरेषु न भयं विद्य
ते क्वचित्॥ सर्वान् कामानवाप्नोति
मर्त्यो देवि न संशयः॥ क्ट स्थ॥
ऊरू ते दिहि विधि द्धु बीजपंच
ब कं॥ फट्कारेण समोपेतं रक्षये
साधकोत्तमः॥ इति श्री चंडोग्र
शूलपाणिना विरचितं प्रत्यंगि
रा स्तोत्रं संपूर्णं॥

श्रीगणेशा

श्रीगणेशाय नमः॥ धरणीगर्भसंभूतं विद्यु
त्तेजःसमप्रभं॥ कुमारं शक्तिहस्तं च म
गलं प्रणमाम्यहं॥१॥ ऋणहर्त्रे नमस्तु
भ्यं दुःखदारिद्र्यनाशिने॥ नमस्तेद्योतमा
नाय सर्वकल्याणकारिणे॥२॥ देवदानवगं
धर्वयक्षोरगपन्नगाः। सुखं यांति य
तस्तस्मै नमो धरणिसूनवे॥३॥ यो व
क्रगतिमापन्नो नृणां दुःखं प्रयच्छति पूजि
तः सुखदो भौमस्तस्मै क्ष्मासूनवे नमः
॥४॥ प्रसादं कुरु मे नाथ मंगलप्रद मंगल
मेषवाहन रुद्र आत्मन् पुत्रान्देहि च्य
नं यशः॥५॥ इति श्री मंगलव्रते संपूर्ण

योजरत्कारुणा जातो जरत्कारौ महाय
शाः। आस्तीकः सर्पसत्रेषु पन्नगान्योभि
रक्षतु॥१॥ तं स्मरंतं महाभागा न मे हिंसंतु

तुम्रह्पा॥ःपस्तिकं धात्रि मतं च स्तुनी
पंथापियःस्मरेन्नारः॥ दिवावायदिवा
रात्रौ॥नासर्पस्य भयं भवेत्॥सर्पापरं
र्पभ डंतो गच्छसर्पविनांतरं॥(३)॥जनमे
जयस्य यज्ञान्तो॥ःपास्तीकः वचनं स्मरः॥ःपा
स्तीक वचनं श्रुत्वा॥यः सर्पोन निवर्त्त
तो॥ध्वा॥शत धा मिद्यते मुर्धा सीसीरब
स्यफलं यथा॥